DPN 6038

Title : अग्नि स्थापन विधि AGNI STHĀPANA VIDHI

Run. No. 6729 Cat. No. 75 Micro. No.

Subject धार्मिक विधि Religious Ritual Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 24 x 10 Folios 2 Lines (in a page) 6

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor पशुपतिमान प:माय् Pasupatimān Pahmāy

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

श्री गणेशाय नमः ॥ अथ अग्निस्थापन विधिः भूरसीति भूमि शोधनम् ॥

श्रीगणेशायनमः अथअग्निस्थापनविधिः भूरसीतिभूमिशोध
नम् भूरसिभूमिरसीदितिरसिविश्वधायाविश्वस्यभु
वनस्यधर्त्री पृथिवींयच्छ पृथिविंदृꣳह पृथिवीम्माहि
ꣳसीः १ अस्माचमेतिमृत्तिकास्थापनम् अस्माचमे
मृत्तिकाचमेगिरयश्चमे पर्वताश्चमे शिकताश्चमे वनस्प
तयश्चमे हिरण्यञ्चमे यश्चमे श्यामञ्चमे लोहञ्चमे सीस

श्चमे त्रप्ठचमे षज्ञेन कल्पन्ताम् २ एषवस्तोमेतिदर्भा
ञ्ज्लाति एषवस्तोमोरुतऽ इयङ्गीर्म्मा न्दार्प्यीस्पमान्नास्प
कारोः एषाषाशिष्टतन्वे वयाम्बिघामे षस्तूजनञ्जी
रदात्तम् यद्देवातिपरिसमूहनंदर्भैः यद्देवा देवहे
डनन्देवाशश्चकृमावयम् अग्निर्म्मांतस्माद्देनसो
विश्वान्मुञ्चात्च ६०